२हीनं ५, ६ १० हीन१ ६ १० छाया१

हीनमंशैर्यथोक्तैर्विनिघ्नम्॥ पंचभाविलग्नमेसंयुतमेकं मेषे भांशहृद्दिनार्द्धविभा
स्यात्॥५॥इष्टभाविरहितादिनमध्यच्छायपादकयुतात्त्वनयांघ्री॥ पक्षसंगुणि
तवासरमाने पर्वपश्चिमघटीगतगम्या॥६॥ रविस्फुटोभक्रवकाद्भिर्योगा.द्वि
शोधनीयः फलवीक्षणोऽत्र सो॥ अक्षितिभागो राहुनार्तसप्तभः फलं कलाराशिगुणतोभ
वेयुः॥७॥ मिघाद्ध्रुवांगगोसलिलकपालादयं करिहृव ॥ घटिकाविधिस्तु
ध्रुवमिष्टच्छायां युगपत्॥८॥ कुसुमफलसुराणां भृर्वमध्यायरा. क्रमश्चाद्युति
विधिर्व्याघ्रध्वकाद्धनाम । निमिषसुरसरितां नक्षत्रवर्गा कलांगैर्भवनदहलमंत्रे

२४२ ज्यो।लि।५ पृ।२८ मा।

ASHA ARCHIVES 3606

प्र.नं.
२

नाग्निप्रस्मारणीनोक्ता॥९॥अतवर्गात स्वमहीसुरवरा: परिहृत्य विवर्तुहृयुगाघटिका:॥अ
पिहृत्य कहृष्ट अनन्तरजा.नभयप्रथितध्वनिकर्णभवा॥१०॥ ॥अन्यप्रकार:॥कोदिकृ
तिध्य२।१०।५आलोकनारातिभगा॥२।६।११गुरुशालाधराका:३।७।१२समुद्राष्टविष्ठ
४।८।१३शारदिदृष्टका: ५।९।१४किलांगुष्ठसूर्वांगुलिस्पर्शेना ड़िकायां तग
म्या:॥११॥इष्टादिनार्द्रगुरोष्टघटीभुक्तपमिते १६।२५घसमिते २५वी।भानिनइष्ट
घटीवसुगुणा येगादलोनतरांशाविधुस्य:॥१२॥अकवटतपयाभयान्तिवर्गा रम
अकुष्ठ शवसंज्ञ खेवराणां।पुगालभयवनपेसमेसमभं.विषमतरोविषमंतत्रध्वचेषे २
॥१३॥ ॥अथमम्मास्मिन्वर्षेकिंभविष्यतीतिप्रश्न:॥स्वेष्टवर्षसहित: शककाल

७३ वर्षेकुशलमस्तु ५

स्ताहतोनयनवागद्गसमेत:।शेषितस्थलनवभिहृतेभमसो०३सत्सलक तं स्फुरमविशे
षमिदानीम्॥१४॥चन्द्रोहिसिद्धिर्युगलेतुरहानि: को॥र्तिश्चिरशेषे३ वृभयंसमृद्ध४
॥सिद्धि:सदाश्रीद्विगप५शैलयो७र्गुनंदा८।हृ८मंकेद महद्भयंस्यात्॥१५॥ ॥
अन्यप्रकार:॥तिथिवारधिष्ण्ययोगैर्युक्त: संवत्सरनामादि:॥पावक ३भिहृते क्षेपा:
१कार्यांस्यानि:२सुखं३चन्द्रात्॥१६॥ ॥पुनरन्यप्रकार:॥वयेशाशी: खर्वसंयुक्तवि
धिविदेकत्रवतन.स्त्रियाह सा२ द्विध४ व्या३ हानमग ७ग३ा८शमितह्विहतम॥
तथाष्टसे दु:खंक्रियतिसकलाभेत्तुमरुसं. दरिद्र्यं मध्ये क्रियति सकलाकतुविजय:॥
१७॥ ॥अथमम्मास्मिन्वर्षेकादशेतिप्रश्न:॥जन्मवर्षसंख्यासहितनागताब्दाद शो।२मि

नानंद ९ हतोग्निशोधात। आदित्य १ चंद्र २ वनिज ३ बुध ४ शौरि ५ पुत्र्या ६ गुरु ७ केतु ८ भग
भो ९ दशाः॥२२॥ फलम्॥ भूमो भीतिश्चो कामयात्मो पुरी धन १ सुखारोग्य वित्तानि भू
पालकन्या २॥ मनस्तापहानि वधारा अभीति ३ धनं राजमानं पुत्रं पुत्रलाभः ४॥
२९॥ कलिर्वधनं हानिरोगग्रहस्ताः ५ पुत्रं मान्यता हाटकादि लाभः ६। अशोबाद्य
बो ३ गन्यतु भीतिर्विदेशो ७ शोकवधनं विभ्रमो राज्यभीतिः ८॥२०॥ महासमर्यदोबाहना
दशानाभोद दशायाः फलं श्लोकपादैर्विचिन्त्यम्॥ अथान्तर्दशा पूर्वं संभाषितेन
विशोधाय वर्षसमानां फलेन॥२१॥ सूर्यो भिने २० सोमस्य ५० गनाम्भि न २८ स्त
केषवोभ ८ द्रागम गुरा ३ इश्व वैरिता: ६३। सोमाभ्भिने २० सोमकरा २० रवय वैना ७० ३

अन्तर्दशा महानिदिष्टो रत्नमनः॥२२॥ ॥अथाह्यानन्नक्षत्राय स्यदशा प्रश्नः॥ वारर्क्ष तिथ्यो
नरनामवर्णो युतानुष्ठिवि स्थानवयभिरई ह्रेषगा:। स्वंमघाडीमत्युकेतुपूर्वादिनावधिस्त्रा
श्रीहिवस्यमाणा॥२३॥ ॥मम्मा स्मिन्मासे किं भविष्यतीति प्रश्नः॥ संक्रान्तिघस्रैर्वि
हीनितवैजन्मर्क्षेकान्वितमंके ९ भक्तम्। रवि कुं १ भि २ शो षरव० फलेपानि:शंत्रो ३
श्रीष्टपुत्रकां ६ ग ७ गरा ८ वषो ४ बा॥२४॥ रवि० कु १ भि २ श कु १ फलेन वपीडा वस्त्रा
ऋहत्मादिगत्नान ३।४।५।६।७॥ ८ षोबे॥ रवि० द १ भि २ शो छि ३ फले ३ र्थहानि
र्धनागमादिग्रगान ३।४।५।६।७।८ दोषा॥२५॥ ॥ममाद्य किं भविष्यतीति प्रश्नः॥
जन्मर्क्षो नदिनभं सैकं १ तिथिवारयुक्तं भगा ७ शिष्टम्। सुखहानि २ लाभ ३ शोक ४ सुख

पसमः६ लाभ७ फलान्यस्मात् ॥२६॥ ॥अन्यप्रकारः॥ नामर्क्षवारतिथिसंयुतिरष्टि७
भक्ता एकादिहो भवसतः फलमत्रशस्तीः २।३।४ः रंध्र९ लाभ११ मथसोकद्ध दुःखवध
रास्थ६ मिष्टान्नभोजन७ मिति प्रफलं निरुक्तम् ॥२७॥ ॥पुनरन्यप्रकारः॥ ग्रहनाम
भमिनर्क्षविहीनं भ२ युतं ह्यति२८ विभाजितशेषतः । आदितो ध्रुवरमे ३।४।५।६।
७।८।९। नष्टलाभावन्यथातिभयरोगविनाशाः ॥२८॥ ॥अथशुभाशुभदिनत्र
य्यः॥ किंदिनमिति प्रश्ने इत्यन्या । यित्रान्नासाहिः२ घ्रागनातिथिइन्द्रकालनगा७ वष्टि
ष्टाः स्युः। सम्पत् १ कलि२ रानन्दा३ कालध४ करुक५ धर्म६ तयाप्ति७ ॥२९॥ ॥ ॥
इति वक्रपाणिरचिते विबुधप्रदीपे प्रश्नतत्त्वे । हायनमासप्रफलप्रश्नाध्यायो हि ४

थमो ऽगात् ॥१॥ ॥अथमध्यहस्तसिद्धिरसिद्धिः शोभनेत्यादितरेषि वहत्ये । सम्यवेदिति
वचांसि मुनीनां सम्यक्तत्त्वलोकनमादौ ॥२॥ ॥कार्यक्रियमाणेसिद्धिर्भविष्यति
वानेति प्रश्नः॥ वारर्क्षयोगैः सहिता तिथिश्च सिद्ध२४ प्रयुक्तावशेषमिते भक्ता । कार्य
सुसिद्धं नष्ट हितांशतुल्ये । सिद्धिश्चरास्या कर२ शोषकेय ॥३॥ आदितु सिद्धं प्रवदेत्रि३ शे
षे कार्यस्य हानिर्निगमाध्व शेषे ॥ स्वाङ्घ्र्यन्य नामार्णितुल्यप्रशेषः सह६ शेषके कार्य
विनाशानं च ॥३॥ सप्ता७ वशेषोहि कार्यसिद्धिः कार्याधिराजप्रमिता६ ५ वशेषे ॥ ना
स्त्यत्र सिद्धिः क्रियमाणकार्ये एवं नितान्तं फलमेव विग्णा ॥४॥ ॥अन्यप्रकारः॥ अभी
ष्टनाडीत्रि३ गुणो ऽपवार तिथिप्रयुक्ता कराविशेषमिताव । गुणोत्रप्रयत्ने कार्ये६ हष्ट८ नेव८

५

शा ११ शेषे सप्तविडल्को ३ त्रहिकार्यसिद्धि:॥५॥ रूप १ द्वि २ वेदा ४ द्वि ७८ शा १० र्क १२
५ शेषे निःवीविडल्को ५ त्रनकार्यसिद्धि:॥६॥ ॥पुनरन्यप्रकार:॥दिनर्क्षहीनं निजभं
गुणेशैकं षण्णाँहतं वायदिनेशभोनं। शुभं ज शुभकाल ८ हतं तु योगो द्वयोरिनाप्त:
फलमुक्तवत्स्यात्॥७॥ ॥पुनरन्यप्रकार:॥आत्मछायाद्वि २ गुणानितिथिवारयुताष्ट
८ शेषिता यंद्र १ नाडी ३ गच्छा रे ६। ५ सिद्धिर्मत्युर्दृगिभे २।८।३ न्यथाहानि:॥८॥ ॥
पुनरन्यप्रकार:॥लग्नवारयुता: द्व द्वनाम वर्णाद्वि शेषिता:।कार्यसिद्धि: कु शेषेस्या
न्नैव सिद्धिस्तदन्यथा॥९॥ ॥इति०।अवितथान्नासिद्धासिद्धिप्रश्नाध्यायोद्वितीय:॥ ५
गात्॥ ॥अथावधिप्रश्न:॥अर्कक्षहीनादिनभात्सकुला रविभिन्न:सर्वशुभप्रश्ननिवये

षवधिंवदेहे।छिद्रया २७ ३ यनो १८० गुलि २० विभाकर १२ दन्ते ३२ भूपे १६ रवौका ९० ३ म
ना १८० प्रतिथिभि: १५० पुरवर्णसिद्धे: २४०॥१॥भूपाल १६ भन्यरवि १२० रवषु १५०
नभो ३ र्क १२० सूर्यै १२ विंशोन्मिते २० द्विज ३२ शिवे ११ नरपाल १६ रवौके: ९०॥आकाश
वासर १५० रवनर्क ६० वियद्गुणा ३० प्राप्तांक ९०० पु २५ [illegible] १५ वियद्दस्र २७० मितैर
होभि:॥२॥ ॥अथविवसाभेदान्नशीघ्राशीघ्रसमकालप्रश्न:॥दौछ्यं माघेन थासा
मं कालं स्थिति क्रियात्क्रमात्।प्र छलग्नवशेनैव कथनीयं विवस्वतो:॥३॥ ॥इति०।
पृच्छाक्रान्तौ छिद्रावधिप्रश्नाध्याय स्तृतीय ३ गात्॥ ॥अथागमनप्रश्न:॥चैत्रादिमा
सास्त्रिगुणा:प्रयुक्ता स्तिथ्यांक ९ भिन्ना:फलमेव तत्स्यात्।कार्यं २ वयाग ३ सफलेतु

मूर्त्तिः ४ सत्सुखं पश्येद् ६ राज्य ७ भिहस्पतिः ८ शमद ॥ १ ॥ ॥ अन्यप्रकारे ॥ जन्मर्भमर्कर्क्षे
विहीनितं वा जन्मर्क्षहीनं दिनभं वसै कर्म ११ नंदा ६ वह्नि ३ रंग ६ तु २ हृत् ३ ४ संपत्तिं
६ को ७ मृ ८ स्व ५ सर्वाण्यस्य वाहनाः स्युः ॥ २ ॥ चित्तलाभो १ चित्तयो २ गज्ञादि ३ भो
गादि ४ शत्रोः ज्ञानमहाः फलानि । ओज्ञानि मंगो ५ ७ पड्राय ६ स्वकष्टं ७ सिद्धि ८ दु
नाष्टि ९ वक्रुस्समानेन ॥ ३ ॥ ॥ अथावधारितस्थलपर्यंतं गमनं भविष्यति वा नेति
प्रश्नः ॥ पंचपञ्चातिथिरिक्ता विश्वयुता वाकि ३ भाजिता शेषा मार्गार्द्धं १ सीमान्तं २
देशान्तं ३ च वैकं गमनम् ॥ ४ ॥ ॥ अथ कस्यापि दूरे गमनप्रश्नः ॥ प्रष्टाह ६
३ निघ्नांक ७ संयुतांश्च वेदा ४ वह्नि ३ हृद्भे हेमलं धौ १ द दिवस्तु मार्गानारं अधिमे २

श्रीश्रीदा ४

नौयात्रा समुद्र ४ क्तिरोगा वा स्यात् ॥ ५ ॥ ॥ अथ नष्टलाभप्रश्नः ॥ वारर्क्षयोगाह्ने
थ युक्ताः पोजाया योगि ह २ मि झ्रा ३ यु ३ त ३ के १२ भक्ताः । शेषं तु प्रश्नाय फलं यथा स्यात् ६
मालोपलब्धि प्रश्नाश्च वदेद्विधिज्ञः ॥ ६ ॥ नाम्नः स्वगवक्रो ३ यानसंस्थितस्य स्वापि ज्ञेने हालयु
ताः कुशेषे । यां यामपर्वो १ स्यजनै विभिन्नं ३ ग्राग वा नों किल्ट गोपि हस्ते २ ॥ ७ ॥ क्रोधा
न्वितः स्वासनगास्ति ३ शेषे प्रश्नात्पमानः करमस्ति ४ शेषे ॥ कुमो भुनक्ती हयारे प रस
तुद मार्गान्तरे ३ द्रेष्व ७ सवाहनो ३ स्ति ॥ ८ ॥ नागेन्दु नत हृदीन हर्षक्रुको नंदेतु ६ हृष्वीपति
मानवार्त्ता ॥ दिक्क १० युती शेषवभे ११ ३ नैष्ठ्यः स्पर्शे १२ प्रष्टुर्व्यासहनिष्ठमीति ॥ ९ ॥ ॥

श्री १

श्री

विलं भादि ३

॥ अथ नौकाप्रश्नः ॥ नौनामवर्णाः गुणिता नाम्ना तिथ्या वारसंयुक्ता युग ४ शेषचिन्ताः ॥ तत्रा
सिवंद्रे १ तलमग्निमग्ना २ दण्डे ३ गुरो ३ यास्यति रवेस्तु ० याता ॥ १२ ॥ ॥ x अथ साटी
प्रश्नः ॥ तिथ्या सवारयुतं दिनं ३ २ युतिगुंजा ८ भा. साटीफलं भवति वै वनिजां वशेष
॥ सम्यक् १ धनं २ फलहानि ३ क्षतिरेव ४ दरोग ५ लाभस्य ६ फलधननाश ७ कलि ८ क्रमे
ण ॥ १० ॥ ॥ अथ लाभालाभौ वा नेति प्रश्नः ॥ तिथ्यः शरः ५ घ्ना द्वि २ विहीन धिष्ण्य ९ के १२
भयुक्ता नव ९ शेषचिन्ताः ॥ लाभो द्वि २ पंच ५ षट् ८ हलो १ त्रि ३ षड् ४ शेषे ७ लाभो न वस्त्रीति
रागिद्६ रवौ ० गतो ३ ॥ ११ ॥ x ॥ ॥ अथ गृहागमनप्रश्नः ॥ तिथिवारधिष्ण्ययोगानां योगो
दन ३ २ संयुतः ॥ अष्टभि ८ हृते कृशेषांक फलमादिशेत् ॥ १३ ॥ चंद्र १ मानं कर

क्रोधः सभीवीनं तृतीयके ३ ॥ वेदे ४ चिंतापरत्वं स्याल्लगेन त्वं पंचमे प ॥ १४ ॥ षष्ठे ६
वेश्मनु गन्तव्यं शैले ७ कार्यमहद्भवे । अष्टमे ८ दोषवत्वं स्यान्नगंतव्यं कदाचन ॥ १५ ॥ ॥
अथ हृतम्बलितो वानेति प्रश्नः ॥ तिथि छिद्र ३ गुणिता धिष्ण्य वारयुक्ता नगा ७ हृता ॥
द्वि २ भक्ता एक १ शेषे तु वलितो वाग्नि ० नृष्फलः ॥ १६ ॥ ॥ विवक्षा भेदाकृतो वाने
तिप्रश्नः ॥ आगतअनस्यनाम्ना तिथिवार भयोग संयुक्ति तु क्ता । कर २ शेषचिन्ताह्वागं
के गतो ३ न्नरिक्ते ० गतो नैव ॥ १७ ॥ ॥ गतागमनप्रश्नः ॥ युग्मं द्वि २ हीने नग ७ छि
ष्टमिन्दो १ तत्रैव दस्रे २ वनिता शेषे । पथो ३ द्व अश्रो ४ नगरे स्थिरं तु ५ पराहृतीह
विध्विचिद्द्र् ६ रवे ० विनष्टः ॥ १८ ॥ ॥ अन्यप्रकारः ॥ तिथिवारधिष्ण्ययामानां योगो द्वाभ्यां २ ह

नक्षिदृ पुष्क।वसुभि १स्तुहरे ह्रागंशे धांके फलमादिशेत्॥१९॥ वंदेतुसंस्थितश्चात्र केतु२
मार्गमाश्रित:।दहने ३ बाहुमार्गेतु जलधौ ४ ग्रामसन्निधौ॥२०॥ शरेचप ५ पुनरा मर्ति
स्तर्के ६ श्चाधितमाकुल:॥ पर्वते च ७ गहे हृद्यं: सिंधुरे ८ चौरसंकुल:॥२१॥ ॥पुन
रन्यप्रकार:॥तिथि: प्रहरसंयुक्तानारकावारमिश्रिता।सप्तभि ७ स्तुहरे ह्रागंशे
षांका स्यूर्ववत्फलम्॥२२॥नष्टसप्ता नामेवस्या नष्टद्रव्यैदितं फलं।पक्षोयमानो
भोद्भूतागमनप्रश्नईरित:॥२३॥ ॥अथकतिदिवसैरायास्यतीति प्रश्न:॥तिथि
धिष्ण्ययोगवारप्रयुतिर्मितैर्वासरै: समायाति।दीर्घप्रवासी द्विगुणोनिकटो द्वि ८
भेद्धामस्तैश्च॥२४॥ ॥अन्यप्रकार:॥लग्नहीनेविधौराशौ लग्ननिघ्ने ३ र्क १२

भाजिते॥सातपोजनना: पांथो यागनालङ्घ्रमाघकै:॥२५॥ ॥परचक्रागमप्रश्न:॥
आर्यामिज्ञात्रु: क्रिय १ कर्क ४ मृक ७ नक्र १० मतैनो सिंह ५ वृषा ३ लि ८ कुंभे ११॥नाया
ति कन्या ६ झष १२ युग्म ३ चापे ९ यद्यागतो वापि निवर्त्तते ऽसो॥२६॥ ॥इतिच
क्रपाणिशरधिनेपितुधपदप्रदेद्रभुवनत्वैवोगमनागमनविषयकप्रश्नाध्यायश्च
तुर्थो ऽगात्॥४॥ ॥अथकस्यादिशिविग्रह इति प्रश्न:॥मूर्त ३ नंत्रि ३ भ [illegible] राशि
धिष्ण्यमैत्र्या: सत्रिग्रह स्थानमिह प्रदिष्टं॥नित्य वनस्थान [illegible]
ऊंमध्यत्रिपुरांतकेनु॥१॥ ॥अथाम्रकदेशादे: क्षेमाक्षेमविचिंतनेति प्रश्न:॥
पापाक्रान्तादिभानिदृश्याद्येर्शाभयुतानियादि।रवौ ग्रा ४० हाति २६ रवि १७ स

भानिक्षयौनरंविषट्६यदानतयोः॥४॥ ॥अथामुकस्यराहुच्छत्रभंगोभविष्य
तिवानेतिप्रश्नः॥ ईज्ञो १३नकोणएस्तेनवांशकेनसैकेनहृत्वं१२ागतुरणा३ ईद्वितुवा
रणाः॥५४॥ग्रासोत्तनो३ल्याहिगताद६नल्या भूयार्कविद्ध्यत्रयुमीनरेखा॥३॥तु
ल्यांभुनाशेकुदशाफलंच पूर्वोक्तयथावधिप्रवदाम्यथाभे०।कुम्भसिंहादिभुविरभंग
घातोवावत्परहीमरणोक्ताहो२।४॥ छत्रस्यभंगाद्विगुणेषुकू३।४।४।५ कृत्स्ना
र्के६तुसिंहासननाशभाद्यैः॥ उत्राष्टयो१कृ१वयावंधनैर्वैनाशे१गुरोर्भा
नयानशोत्वा॥५॥ ॥अथामुकस्यलोपरचक्रंभविष्यतिवानेतिप्रश्नः॥विध ९
याभिधानसंख्या.नष्टाहृपाद्यपक्षपत्रनयुक्ता।कुम्भगुर्विभागनवेशोवान्त

स्वनु

परचक्रंनैवपरचक्रम२।६॥ शुभाशुभप्रश्नः॥शुक्रादिनित्यागतवासराव्धानंदै
२युतारामनुविभाजितानष्ट।एकावशेषेशुभराजलोके स्यान्नादिमत्यगतोद्वि२
शेषा॥७॥ त्रिशेषकेभाग्युदयोविषष्ठस्तत्रैवचतुर्थपत्रसंस्थः॥५॥ ॥जयपराजय
प्रश्नः॥ प्रश्नाक्षरसमायुक्तं दुर्गानामाद्वि२भाग्रतम।याथीजयीवराहोशेषस्थायी
नि:शेषके०।२ जयी॥९॥ ॥अथकोटकोद्ग्राहइतिप्रश्नः॥ग्रामेनराख्याः सयुतिः
स्त्रीत्याद्युकानगा७ पाद्गदध्वविनाव॥संग्रामकर्त्रीरभयद३यक्तः२ह्यन्यः क्रमा
त्कथितकरान्तिरिष्ट॥१०॥अथकोट: कस्यांदिशः स्वपतीतिप्रश्नः॥वैशादेद्विगुणा
मासायामाहष्य निताप्तनः॥यत्तशिष्टहेदुगांशेषस्वपतिसर्वतः॥११॥ ॥अथ

कस्यां दिशि वैरिणुरिति प्रश्नः ॥ तिथिनक्षत्रवाराणामैकं वेद ४ समन्वितम् । अष्ट
भिस्तु हरेद्भागं शेषे वैरिणुरुच्यते ॥ १२ ॥ ॥ अथ दुर्गे कति मनुष्याः सन्तीति प्रश्न
॥ तिथ्युक्षवारघटिकाः प्रहरैः समेता दुर्गाक्षरैश्च सहिता हि गुणा गजाप्ताः
॥ एकादिशेषे वसतश्च खवेदपूर्वी दुर्गे स्थिता प्रभवतीह मनुष्यसंख्या ॥ १३ ॥ ख
वेदा ४० खशैल ७० शतं १०० खबाहस्ता २०० सहस्र १००० सहस्रद्वयं २००० वा सहस्र
त्रयं ३००० दशकालाधिकां कानुपातेन यत्नत्तयामत्रापि पृष्टया ॥ १४ ॥ ॥ अथ घसूव
ल प्रश्नः ॥ स्वामिवर्णाहिहितं तिथिवारर्क्षसंयोग इह भ्रमितसमेतः । नित्यमेवाधिजयः १०
१ खलु सेषि २ मृत्यु ३ रग्निविहतौ विधुतः स्यात् ॥ १५ ॥ ॥ अथ षष्ठपंकस्यां दिशी

ति प्रश्नः ॥ फले वसित्तु ४ धनखराभ्या २० काले द्विरामा ३० चांतेगमिता हृष्टघाते ॥ यथोत्तरं
नेवलिनश्वातियाप्युताः स्यादेषपष्टे हतादिवर्णाः ॥ १६ ॥ ॥ अथ सन्धिर्भविष्यति वा
नेति प्रश्नः ॥ शुभालिंगिनादूक ७ कंन्या ६ नृयुग्म ३ घटा ११ श्च यदा लग्नहिनाक्षरे तेषु ॥ य
दाद्रव्यं नेत्रं ० धनुर्वा ११ कर्कश्वा १० नदा सन्धिः काम्यथा विग्रहः स्यात् ॥ १७ ॥ ॥ लो
हं कुत्रेति प्रश्नः ॥ तिथिः पंच ५ युक्ता धिष्ण्यसहिता रामभाजिता । वंह्द १ जले करे २ श्मा
मे. व्याप्ति लोहं त्रि ३ शेषके ॥ १८ ॥ अथ आस्थितेसे व्याधिः भावीति प्रश्नः ॥ प्रोक्षितेनु सेन्य
स्याविप्राविप्रश्नोवा ॥ सूर्यदृष्टहीनं दिनभं त्रि ३ विशिष्टं हरागिनि हृतितर्क ६ वृद्धिनो ०
। यत्राग्निहानिर्भुवि १ लोहमानात् लोहं वनासिद्धि २ रिहाग्नि २ शेषे ॥ १९ ॥ ॥ अथ वे

हितदुर्गेहत्तान्तप्रश्नः ॥ धोरे राज्ञ नाति थिरं हि १ दुष्कृत नक्षत्र वृषकाव स्तुभि २ विभ
क्ता। आयाति दुर्गं प्राति वैक १ शोषे ६ क्षे २ पंच ५ षष्ठे ६ धुविपन्न वनृपः ॥ २० ॥ रामे ३ भ
धंस्या ज्ञलरो हि ४ शेषे स्वीयस्य सैन्यस्य पलायनं नु। दुर्गेभि हृदन्न गा ७ शेषके ८
अष्टा ८ वकेषु नु गृहीत एव ॥ २१ ॥ ॥ अथ विवक्षो भेदात् दुर्गं आप्तिर्वा नेति प्रश्नः ॥
रामे ३ गुणित वार सुतारा युक्ते त्रि ३ भाजितः ॥ वद्धे १ आप्ति र्द्वि २ नेत्रे २ त्रि ३ हीषे ३
नैव संभवः ॥ २२ ॥ ॥ इति वक्रपाशि र चिते विबुधपदप्रदे प्रश्नात न्त्रे वै प्रथु प्रश्ना
ध्यायो न पहितद: पंचमस्थागात् ॥ ॥ अथ मृगया प्रश्नः ॥ रवयुत विधुं सैकं गो गो ११
येत् खंजः १ सुतनुः २ खंजः ३ सुतनुः ४ । कारणः ५ सुतनुः ६ खंजो ७ ३ नयनः ८ खंजः ९

सुतनुः १० कारणः ११ सुतनुः १२ ॥ २ ॥ खंजो १३ नयनः १४ खंजः १५ सुतनुः १६ कारणः १७ सु
तनुः १८ खंजो १९ नयनः २० । खंजः २१ सुतनुः २२ कारणः २३ सुतनुः २४ खंजः २५ सुत
नुः २६ खंजः २७ क्रमशः ॥ २ ॥ यत्नादन्ना भो भवेत् खंजेन लाभः सुतनाविह । कारणेना
मोहाने नैव तु लाभो गमनमात्रतः ॥ ३ ॥ ॥ कामृगये ति प्रश्नः ॥ अश्वे १ भा २ उष्ट्र ३ म्ह
षी ४ फणी ५ कुक्कुर ६ मार्जारो ७ तु ८ मार्जारको ९ गोधा १० मूषक ११ गो १२ महिषा १३
इहसिंहः १४ कासरः १५ केसरी १६ । खरो १७ गौ १८ कुक्कुरः १९ कपि २० नैकुलको २१
वभ्रुः ० कपि: २२ केसरी २३ अश्व २४ सिंह २५ पक्षि २६ करी २७ इति मृगयायां वाच्या प्रति नी
तः क्रमात् ॥ ४ ॥ ॥ अथ विष्टद: ॥ मेषादितो गुरोर्वश्या पित्रे पि सिंहे भगो ३ योगाः । नोय

विश्वे कपि विन्ते पाखुर्व पुरजां त्रिभे ॥५॥ ॥अन्यप्रकार ॥ मृगः १ कासरो वानरः सर्प
सिंहो कपिर्वानरः सर्पगा वो वृषभः । कपिर्मीनयुते मनामे प्रश्ने स्तदा धाहिल छिभूवे
नीतमात्रा ॥६॥ ॥आशासरव्याप्रश्नः ॥ वारयुतेभे आत्मा विवि घ्रु । नारक २७ शिष्टप्र
शान्उक्ताः ॥७॥ अन्यः प्रकारः ॥ तिथिवारयुतिर्विधु २ निता दलिता भीष्ट घटी वि
भाजिता । अवशेषमिता ऽश्वजन्तवो दलशेषवपलायने मृगः ॥८॥ ॥पुनरन्यप्रका
रः ॥ तिथिवारयुतिर्विधु २ निता स्वहृताबेदलिता भ २७ शेषिता । अवशिष्टमिता अश्व
जन्तवो दलशेषवपलायते मृगः ॥९॥ ॥अथारोग्य ककन्तुः शुभाशुभप्रश्नः ॥ जन्म १२
क्षहीनं दिनभं वसैकं २ नन्दा रवशिष्टं स्खलनं कुत्र्ले ६ः २ वत्र रोगे वे ३ पतनं प्राहतुप

शैलैं ७ गभेदः शुभमन्यथा स्यात् ॥१०॥ ॥इति व क्रपाशिरवित्ते विवुधपदप्रदे
प्रश्नतत्वे त्रितुत्र्त कहिन दोह्नगया प्रश्नाध्यायो हि षष्ठो ३ गात् ॥ ॥अथ रोगप्र
श्नः ॥ मंदाग्निशूलवातज्वरक्षुधाहानयश्च वैवर्ण्यम् । कटिमूर्द्ध कुक्षिपीडा वृ
कष्टमेषलग्ने स्यात् ॥१॥ ६ः स्त्रिषु शूलशोषज्वराः कपालाक्षि कटि हृत्स्वगात्र । अ
निलविकारो ३ वेला ज्वर उदये युग्मलग्नस्य ॥२॥ कर्कोदनहास्यूमौ नानिश्रान्ति
कपालपीडा स्यात् । शीतज्वरो ३ रुधिरपित्तकरो हृदि वा यथासिंहे ॥३॥ कन्यायां
मंदाग्निक्रोधालस्याहविज्य रपित्तहृजः । ३ रवरो धनेत्रकर्णी जिह्वा बाधाश्च निर्दि
ष्टाः ॥४॥ युके शूलश्लेष्मानिलपित्तो हृद्गतापवाधास्यात् ॥ कीटे ज्वालादि हेन्नेषमसा

वौक कुक्षि हृतः॥५॥ वायेशो धस्तापोवक्षसिवाम्हर्ङ्घवापिपीडास्यात्॥ मकरे नापस
मीरदेहधिभंगौगपीडावा॥६॥ कलशेन्तुवधिरत्नांग मैनेवेहस्तपादद्दाहस्यात्॥ स्वा
दनमपिचत्दशानांमस्त्वरत्नारोगोगोरोगाः॥७॥ ॥रोगस्था नेमृतभेदः॥ शीर्षेमुखे
वाकुहृदयोदराणि कटिवस्तिगुह्यसंज्ञानि॥ ऊरूजानुकजंघेचरणो स्थानानि मेषात्स्युः
॥८॥ ॥अथदोषप्रश्नः॥ धिष्ण्यवाररामतिथियामदिशांवे. संयुतीहृदउ३२ पृथुनागत्रट
भक्ता॥ पितृदोष ३ हृहृगाउ२॥८ शेष रामघाटकामिते ३ ७ सुरदोषः॥९॥ मत्तदोष १३
उदितोपुगातकैं ४॥६ मृद्नीशारमितेव १॥ पात्रिदोषः॥ तर्पणार्वनबलिप्रविवारै स्त्र
सान्निरूहदिनानुमिवर्यैः॥१०॥ ॥विशेषप्रकारः॥ मेषागारिप्र १ धीर २ शाकिन्या

स्थाउ३ वडाकिनीध४ जलतुरः ५ पितृवन६ मातुल७ नगर८ भाषित९ जल१० धी
१११ रक्षांसि १२॥११॥ ॥अन्यप्रकारः॥ अजेष्ववत्रोवैहषे बामदेवीनयुग्मे ३ महे
शीकुंभे ४ शाकिनी च ५ वलिष्टे ५ जलब्रेतउ की ३ वलायां ६ ग्रहे १ कु७ मेषेत्रपा
लो ३ लिपे ८ ३ हि॥१२॥ धनुष्यंगजश्चारिडकानक १० लग्ने ११ ब्रेतउ कोऽपे १२ योगि
नीयै॥ कुशान्तिर्बलिः पूजनंतर्पणं वौषधंवैतियोग्यातुहृषेयोगतृप्तिः॥१३॥ ॥
पुनरन्यप्रकारः॥ प्रश्नकव र्गो द्वि २ गुराान्तचावेदाध हतायोगइहोभयेवार॥
ग्रहे २ विभक्तः स्ववरेहिशेषदोषेकुवोरादि कुथाविषैस्यः॥१४॥ रवौ हृदिष्टसंपात
जोगोस्यइन्दौकुजेशाकिनीजोउ धेगाग्रेजस्यात्॥ गुरौदेवजोभार्गवेशाश्वरोग्यः॥ शनौ

मनुष्यो डाकिनीग्रस्तो हि। हृत्वा पृच्छकनामवर्तीनि हि दैवास्तन स्वामिन नष्टा पितृव्याधा भवंति॥१५॥ ॥अन्यप्रकारः॥ रवौ क्षेत्रपालो याति सौम्ये भद्रदेवी कुजे शाकिनी बोधने रायदेवी गुरौ निर्जरो भार्गवे नीरदेवी शनौ अंतरे ३ वा मन्यपोः प्रेत एव॥१६॥ ॥साध्यासाध्यप्रश्नः॥ रोगीप्रष्टा प्रश्नावली अष्टौ ते एकीभूताः रामसंख्या ३ विशिष्टाः। वेदे १ साध्याः कष्टसाध्याः करे २ असाध्ये ० ३ साध्यो मृत्युरेव नामये न॥१७॥ ॥जीवनमरण प्रश्नः॥ तिथि वार संयुक्ता तिथि धाकि तापा॰ यम २ रामा ३ द्विगुणा नगा ७ हृत तस्य शेषे विहन्ताहे वियत्ति॰ हन्ति हरा न नश्यरमो विनाहन्ति मृत्युः समग्र०।०।०॥१८॥ ॥ १४
अन्यप्रकारः॥ प्रश्नाक्षरांगान्गुणिता तिथि पंच ३ पद्मा नष्टा ८ हृता निकिलली

क ३ विभाजितानि। शेषे विद्धौ १ भवति दुःखमथो करे २ वा आयुर्भयः परि मितो मरणं स्वरूपम्॥१९॥ ॥पुनरन्यप्रकारः॥ हृतस्य नामाक्षर योगसंख्या त्रिघ्नी गजाघातस्समत्र शेषे। ऋणेव २।४।६। मृत्युर्विषमे १।३।५।७ तु नैव पुन्ये हि रोगस्य हंति हृता॥२०॥ ॥पुनश्चान्यप्रकारः॥ वर्णा द्विर २ निघ्ना गुणध संयुक्ता रामै ३ र्विभक्ताः फलमत्र शेषे। वेदे १ नष्टं तु स्थिर रोग ३ कष्टो दर्षे २ गुणे ३ स्यान्मरणं स्वरूपम्॥२१॥ ॥पुनरप्यन्यप्रकारः॥ रोगाभिधानं हृता रसी संयुक्ताः करभाजिता॥ शून्य शेषे भवेन्मृत्यु रेकशेषेत दन्यथा॥२२॥ ॥रोगावधिप्रश्नः॥ तिथि ३ गुण ३ रसैः ६ द्वि याचन ले ३ शशि २ विषय ५ गुणा ३ र्तु ६ पंच ५ वसु ८ पसाः॥ विद्धेयपकर बन्दु १ भतनाप ३ तो वाधुभिः ३ कृ ॥ २२ स्थिर २ वसु ८ दहनाः ३॥२३॥ भूतप

मात१००पक्ष२वसवो८हुताशि३रा३रवेति नारकाणामनम्।क्रमशोऽश्व्यादीनां का
लसाएमानेन॥२४॥इत्याहसंहितायांवराहमिहिरोमहीयसां मान्यः॥आमय
दिवसात्सकलः प्रभादे श्योगतो वापि॥२५॥ ॥अन्यप्रकारः॥नवेद४शां११कट४शू
पां७शा३०म१ध्व३द्वि७सप्त७मितिस्वर्ग२म१ध्व३द्वि७घ्नेत्र५शा११नाशाः॥तिथि
१५हेयर्थम१ध्वं३क८म१त्वं२श२०सर्व११भु१५रुद्रा११३नत्रैलो७स्वरा अश्विनीतः॥
२६॥ ॥अन्यप्रकारः॥नवेद४शां११क८स्पपां७शा३०म१ध्वंद्वि७सप्त७नक८स्वः२१
दिसनेमछिमास२११५भु१५घस्राः१५भु१५मासद्वय६०स्वर२दि१०गिंद्रां१४
क८घस्र१५समित२१षष्ठि६०पत्रो१५शा११घस्रा१५३३स्तीर२लोः॥२७॥ ॥ २५
पुनरन्यप्रकारः॥गुणाः३कष्टमेके१भु१५मस्ता७३नकाष्ठा२०दिग१०३नागा८सं

ले७शा११वन्हे३भु१५नित्याः१५॥अरे५नन्दा९गि३सूर्य१२भु१५परवद्धं१५०क८भूपे१६
भु१५कष्टा३के१२स्त्रीला७इत्येष्वश्विनीतः॥२८॥अवधित्रयमेतदामयस्यात्कथ
नीयंभवतीति वाडराधाः॥अथनास्तियदामयस्यैवेनात्रनयंप्रभवत्तदापि
वाच्यम्॥ ॥पुनरन्यप्रकारः॥दि१०द्वाक२१सप्त७गज८पंच५सप्तमिर२१नगा
७गा७ध्वंद्व१भु१५नाव२५तमिथो२१भुदशा१०भु१५तत्वाः२५॥दि१०घस्र१५
नव२५नख२०षष्ठि६०मिताभु१५विश्वा३स्वर२१भूप१६वासर१५गजा८ःप्रथ
मर्क्षतःस्युः॥३०॥ ॥पुनश्चान्यप्रकारः॥धृति१८भूपति१६नन्द९भूप१६नाका२१
स्थापनो१२रसर८विश्व३नागवंद्रा१८।अथनत्व२५नगा७वतार१०नागा८३३म

नि २२ भरणी १६ धनि १८ रादितो ग्रभान्तं ॥ ३१ ॥ ॥ पुनरपि वान्यप्रकारः ॥ गजाः ८ हय
गौश्व सम्भनाकाः २२ स्वर्गी २२ पंच ५ मही १ युगाः ४ ॥ सिद्धा २४ अष्टेन्दवो १८ देवी २०
नाकाः २१ अंशा ३० स्तनौः क्रमात् ॥ ३२ ॥ ॥ इति चक्रपाशिरचिते विबुधपद्म
देशप्रश्नतत्त्वे रोगप्रश्नाध्याय सुगमतरः सप्तम्याणाति ॥ ॥ मित्रविनाशक्षे
भस्थाति कालिमर राणा निर्भीत योवद्भृत्याः । आयन्त आलये लिनस्याल्पमतो वदा
स्तिवा नास्ति ॥ १ ॥ इति हृष्टे देवज्ञो निपुणमति वैशम्पं प्रतिब्रूयात् पुष्यनदी
देवफल संज्ञा कारयसवर्णमुत्तवान् ॥ २ ॥ इत्यपि वेश्माधिपतिः सवर्णमनुजांश्च २६
रं प्रति ब्रूयात् ॥ पुष्यनदी देवफल संज्ञां कुरु सवर्ण भावेन ॥ ३ ॥ इति वादितः सव
र्णाः नि: श्वे कोहाक्षरन मुद्रा विरमित ॥ तक्ष्णु खादे वस्त्र ओ वधार्य ग्रल्पस्याति ब्रूयात् ॥

ध्याय इन्द्रक आग्नेये याम्येन स्तुयात् धानेस्यात् ॥ स्तनो येहि वायव्योस्मः श्रीद्यः शि
वैशान्तः ॥ ५ ॥ कश्चिद्दहाहफल पुष्यनदी पूर्व वर्णात्तत्त्रिधा । नास्ति हि सवर्ण
भावो वर्णोस्थितिवप्रतीतं सत् ॥ ६ ॥ नरखर वानर कुक्कुर स्तनप पुरुष छिद्रभल्लु
काः सान्तम लोह भस्म कपालं ज इरिन भिति संज्ञया शल्यम ॥ ७ ॥ मत्स्य दण्डोम
धुभयं प्रवासो विपत्तिरिक्तम् ॥ ग ॥ धननाशश्च कुलस्य इति क्रमशः फलं तेषाम्
॥ ८ ॥ ध्वरनरो वास्तनपपशु जातिर्वैनिकुत्र विहङ्गम । नरउरगाभीः पशोन्नस्य भ
त्तया याने ॥ ९ ॥ साई कर १ ॥ वेकथ्यां कथ्यां सनेम करे १ ॥ हसने मकरे १ ॥ करवत्त हृये ४
कटीयक टेशाल्पमानं नं ॥ १० ॥ करवत्तु हृये याने हस्मात्राभिति कायद्धवनभेदः ॥ अ
कटौ १

न्यगतुल्यमेव विप्रा सो हेतुरिह वाच्यः ॥११॥ ज्ञात्वा ह्यन्यस्थितिं नैवेलोकाधीशान् ॥ प्र
हस्य विधिवद् ध । मंत्रेणाशिरवांवध्वारयनकानां कारयेत खननम् ॥१२॥ दत्वाऽर्घ्यं
वा दैः धरणीधारिणी नित्य नमोऽस्तु यात ॥ तदनु हि विधारिणीं नित्य करराभ्यां नमः
स्वाहा ॥१३॥ इत्यनेन मंत्रेणायं सिद्ध्यति कुहाकः पवेशमध्यभागे । दिक्कल्पना प्रपूर्वे कु
ननवरवले खनेत् कृत्स्नम् ॥१४॥ उद्धृत्य तत्र शल्यं सम्यक् नि कं प्रक्षिपेत् खनने चादौ ॥ सं
शोध्य पञ्चगव्यैर्भूमिं शान्तिर्भवेद्देवम् ॥१५॥ पुनरेवं भयवेत्तृ स्थाने ह्यपि हि द्विवार
मपि कार्यम् । कश्चिद्विभागमात्रं दृष्ट्वा तेऽ योनान्यथा ह्यल्पम् ॥१६॥ ॥ इति वक्रपा ७
शरवितेविकधपदप्रदेवस्मिन्नवैग्रहशान्तिकरः शल्यप्रश्नाध्यायो ऽष्टमस्त्यागात् ॥

अथात्र द्रव्यमस्ति वा नेति प्रश्नः ॥ ॥ भौमशनिव्यतिरिक्ते दिनेऽद्य यामादि विरह
वेलायां । प्रश्नोऽयं सुपरीक्ष्यो दारिद्र्यध्वंसको यस्मात् ॥१॥ अभ्यस्य हृद्गतं दीप
शिखाप्रायं चिदामहः शैवं । ध्यात्वाऽभ्यर्थ्य प्रवदेत् कुसुमेन्दुकादर्वर्णेन ॥२॥ कन
कराल्यो रौप्यताम्रसीसककांस्याररंगलोहाः स्युः । अएकवटतपयशानां दिश
श्च पूर्वादिमध्यान्ताः ॥३॥ शल्यवद् द्रव्यं स्याद् पञ्चरागकवर्गवेना यस्मात् ॥ नि
वास एव वदमिति कश्चिद्दहं वञ्चितस्तत्र ॥४॥ ॥ इति ० द्रव्यप्रश्नाध्यायो भगात
धनलोहिनवभोगात् ॥ ॥ अथ नष्टवस्तुप्रश्नः ॥ नष्टार्थमर्त्यवर्णा लग्नपतिना र
मरुभाजिना क्रमशः । धातुर्मूलं जीवश्चन्द्रार्कक र २ भौम० ज्ञ भैवे ॥१॥ ॥ नि ष्ट

ऊनं कर्त्ते इति प्रश्नः ॥ स्वर्यस्य हीनो दिनमंतु मेषकं १ याम इष्टु कंदरा १० संगुणांव त्री
क्षणांशुभिः १२ शेषितमकर्त्ती वै. वाक्यं क्रमेणोवहि वक्ष्यमाणम् ॥ २ ॥ भौमो १ बुधार्के २
खलु लोकमध्ये ३ धान्ये ४ तु चस्थान ५ अयोकरोषि ६ ॥ अब्जे ७ ववल्ले ८ अथ चौरहस्ते
९ वन्धौ १० पतंगे ११ स्वगृहे १२ स्वनष्टम् ॥ ३ ॥ ॥ अथ चौरप्रश्नः ॥ भिन्नैः स्वीयैः पार्श्वे
देशावप्ये गेहपार्श्वागार एवंतु कुर्वै । मेषान्नीतं स्थापितं स्थापितं वै. यावत्तत्तीराशि
वक्रस्य तावत् ॥ ४ ॥ ॥ अथ मार्गमानप्रश्नः ॥ तत्त्व २५ योजनमितं वरे ३ ध्रुवांवंड १
योजनमितं दले १२ शौरिस्थिरे तद्दलं ६ । छिद्रपूर्वीरितं बुधे. मार्गमानं विषये तनावि १८
ह ॥ ५ ॥ ॥ जातिप्रश्नः ॥ छिद्रे जौ सिते जावथस्य भौमे नाभी विधुर्विद् विबुधस्तुम्

ढः ॥ म्लेच्छाश्रमन्दस्य गुके तत्त्वो थो. लप्रे ष्वराश्चापि भवन्ति काले ॥ ७ ॥ ॥ अन्यप्रका
रः ॥ विप्रा हि क. क्षो ४ लि ८ क्षया १२ श्वना भ्या ३ ज ११ सिंह ५ वापा ९ हि र्विशो छि २ वृष १०
६ दश १० न्तु कुम्भ ३ मक ७ धुधरा ११ स्व्वमृ ६ का. वडुवेशा ज्ञातिरिह प्रदर्शिता ॥ ८
॥ ॥ पुरुषोवास्त्रीति प्रश्नः ॥ जीवराहुार्क केत्वाराः पुमांस स्त्वन्दु भार्गवौ ॥ स्त्रियो
बुधशनी ग्रहो ग्रहात्लग्नेश्वरादपि ॥ ९ ॥ ॥ अन्यप्रकारः ॥ गुरौ ३ गुणिताः प्रश्ना
र्णांस्तन्मात्रा वेदध संगुणा एषाम् । योगः शिष्टो तामिः ३ पुं १ स्त्री २ खण्डाः क्रमाद्बु
ध्वातु ॥ १० ॥ ॥ अथान्यत्साधारणम् ॥ मेषो द्विजाति र्वृषभे च नाभि र्युग्मे च वैश्या वि
धुभे च शूद्रः ॥ सिंहेन्त्यजो वा ध्वजन त्रियो स्त्री युकेन्तजो वांगभवः सखा वा ॥ ११ ॥ की

टेनुभः योपि वा श्ववो वा । वापेनुङ्गो वा युवतिः कथं चित् । नेत्रे रवर्गो माज्वगराश्चवेश्या
वा कुम्भ आत्मा ३३ खुरिला नपुंजी नेत्र ॥१४॥ वलि पष्ठे प्राडुरागः कश्चिदास्य केविमर्द
का । मातुलानीति वापि वैमष्टगे ३ रिवो वनस्थलम् ॥१३॥ ॥वर्णप्रश्नः॥ पाटलो ३ कोवि
धुर्गौरो ३ सूग्र रक्तो नील इन्दुजः । पीतो गुरुः सितः शुक्रो न्ये नीला लग्नपा क्रमात् ॥१४॥
धुविङ्गदः ॥ गौर रक्तो रवि गौरश्च चन्द्र आराः सितः सितः । श्यामो ज्ञो ३ न्ये ३ सिताभाः खु
र्ग्रहा ध्वजपते रपि ॥१५॥ ॥अन्यप्रकारः॥ वृषालीसी नोपाटलो मेषकर्क कौ धवलौ
धनुः पाण्डुरा स्त्री पिशंगो । मृगालिा ङ्कवौ कर्बुरो ख़क कुम्भो हरिद्युग्मराशिर्वली पीत १९
वर्णः ॥१६॥ ॥स्निग्धरूक्षप्रश्नः॥ स्निग्धा मिथुन ३ कर्क ४ धलि ८ तुला ७ कुंभ ११ झषा १२

मता: । रूक्षा वृष २ भ कन्या ६ अ १ सिंह ५ चाप ९ मृगा १० स्ततो ॥१७॥ ॥वयःप्रश्नः॥
स्थूरो रविवैस्तनयः शशांको वालः कुजो श्च कुमार उक्तः । वाचस्पतिर्मध्यवयो ३ वा
नुशुक्रो ३ तिवृद्धः शनिरंगपास्यात् ॥१८॥ सूर्यादिकग्रहाश्चापि वयोक्षेयं बुधै रथ ।
दिवाकर सुतः श्लोकः प्रकारान्तरं उच्यते ॥१९॥ पञ्च ५ कोष्ठ १० न्टपा १६ स्तत्त्वा २५
रदा ३२ खाद्रि ७० भुजा द्विपो ८२ चन्द्रारे ३ अपशुक्रार्क पंगूनां हि क्रमाद्वयः ॥२०॥ ॥
अन्यप्रकारः ॥ वर्णो राशिर्हितः सूर्यैः २ मात्राभिः सहितस्ततः ॥ शिपलीपु रवहृतः शेष
वयो भावः प्रजायते ॥२१॥ वालता स्यात् महीशेषे द्वि २ शेषेतु कुमारता । त्रि ३ शेषे
प्रौधता वेदे ४ वृद्धता रवे ० उतिजीर्णता ॥२२॥ ॥एतेषां मध्ये कतमश्चोर इति प्रश्नः ।

शंकितजनानां नामवर्णा छि२ हता अब्धिः समुद्र४ घ्नाः। योगशेषांभक्तो जनसंख्यया ज्ये
ष्ठतश्चौरः॥२३॥ ॥अन्यप्रकारः॥ संकितजनसंख्या यानष्टाभिर्धास्वरोदयप्रयुतिगु
णा छि२ गुणा त्रि३ युताभक्ता जनसंख्यया ज्येष्ठतश्चौरः॥२४॥ ॥पुनरन्यप्रकारः॥
लग्नात्यं वांगसप्तानां भानां योगो जनैर्हतः। स्वदष्टाकृशाये तेषां चौरो यत्र समाप्यते॥
२५॥ ॥अथ कस्यां दिशीति प्रश्नः॥ लग्नं वा चन्द्रराशिं वा विभज्य युगसम्मितैः ४॥ ए
कादिशेषतः पूर्वयाम्यतोयोत्तरा दिशः॥२६॥ ॥अन्यप्रकारः॥ वारप्रयुक्ता तिथि
रंकै९ र्युक्ता वेदा४ वशिष्टा गगनाद् दिशः स्युः। काष्ठा स्तथाष्टा विहनष्टदासादि प्रश्नके ा २०
कांकवशादपीन्द्रात्॥२७॥ ॥कस्मिन्स्थल इति प्रश्नः॥ मेषागारे तु मेषस्यान्तत्या

गारे तु मन्मथे। वृषे गोष्ठे वदेन्नित्यं जलपार्श्वे मृगास्यके॥२८॥ जले लिकर्कमीनेषु वने
मृगेन्द्रकुम्भयोः॥ पथि कोदण्डके चैव कन्यायां तु लमीष्यते॥२९॥ ॥कश्चिद्भेदः॥
मेषप्रवारभूमौ मेषे एके किलायणायतने। मिथुने संगरगीतन्त्र त्यस्थाने स्त्रियां क्षे
त्रे॥३०॥ गोत्तिकभूमा वथवा कुंभे शिल्यायतनगतं वा ग्रामम्॥ कीटे संगरवारभूमौ
वा रवणचापे वा॥३१॥ ॥अन्यप्रकारः॥ भूमौ१।५।९। क्षेत्रे २।६।१०। चित्रस्थाने ३।
७।११। तोयादौ ४।८।१२ राशौ आदेक्षितैर्मम्॥३२॥ ॥अथनष्टदासादिप्रश्नः॥ चैत्रादिमास
तिथ्या३ द्यो४ धतृथिः क्षेप्याद्युगा अपि। हृद्भागं गजे त्तत्र शेषस्यैव फलं दिशेत्॥३३॥ नष्ट
स्यैतकरे रत्नागो८ वेद४ षड्६ वह्३ रपैत। हरवान्तागुणाशोले ७ पिधौरवारो पयन्तम्

हस्ता२ हस्तप२

णान॥३७॥ ॥अन्यप्रकारः॥हरेगन्यादे।पित्रभादेसमीपेस्वग्रामेवाश्रयके हस्तभा
स्ता२ दे।प्राग्भादेवांतिके३ इत्थं इत्थं द्रव्यामवीशामेसंक्षयस्थ॥३५॥ ॥पुनरन्यप्रका
रः॥स्वर्वाविर्हस्ता।मिस्त्रयोन्त कोदकद भास्कर२रसाशि।दिनभान्तंनप्राप्तिप्रत्यागंना
नयागंता॥३६॥ ॥अथनष्टग्रामेवानेतिप्रश्नः॥नेदवृतांगेयेकुभयुक्तं।लाभइहस्या
भष्टवसोर्वै॥३७॥ ॥अन्यप्रकारः॥रामेनितं३दिनर्क्षेवकला।देसिकरमन्यथा।य
थाक्षितेपुरोध्रुर्क्तं।शेषेवेवफलंवदेत॥३८॥चंद्र२शी३हिलामः।स्यात्करे२वानि
श्चयत्वतः॥शुद्र२ भवशां।रामे३ऋत्याशीनाविधान्मितं॥३९॥एकादिनेदिशोध्यसा
द्धेयाइतिसनोमनम्॥अस्मादेवावधिज्ञानमथक्वाचित्कथ्यते॥४०॥ग्रुमासवर्ग २१

शिणुरागंगचंद्राः३।६।२रसांकवज्राः६।९।२नवभास्कराकाः९।१२।२नरवावनारा।द्रु
यर०।१०।४एकतोवासमाज।२रामे३नुगेगजा८भ्रुवाध्या॥४१॥स्वल्पत्वादवधेस्तु
र्वैवालाभव्यक्तिदर्शनात्।लक्षणुरेधतश्चैवकथनीया३वधिर्बुधैः॥४२॥ ॥अन्य
प्रकारः॥पक्षमासत्तुवर्षा३दिवाराश्चोयथाक्रमम्।प्रहरात्कालमानेस्यात्प्रदिवे६
स्थानेआगतः॥४३॥ ॥पुनरन्यप्रकारः॥घर्मा२पकद्वदीक्ष्वरैरामे३वर्ष्याध्रा
शाकुनेौ३रा३०वकु मासश्चैला:७॥नोनेौ३द्रुध्वभ्रा।विश्व१३नहस्त२नोमोवाराणा।पनभ्रु१
रेल७नुगा७सुदाप्ताता॥४४॥ ॥इतिवक्रपाशिरयिनेविबुधपदद्वंदप्रश्नतत्वेवे।
अवितथोत्रनष्टहृतप्रश्नाध्यायोहिदशमो३गात॥ ॥अथविवाहप्रश्नः॥प्रश्नाग्रु

अप

भद्रं नित्यभं त्रि ३ शिष्टं स्वर्गस्थिरा याँ वलिस द्मनीन्द्रोः १।२।३। स्यान्मनमथो भूमिगतेतु
त्तस्मिन्वाथ्यं विवाहस्थभविष्यतीति॥२॥ ॥अथ सन्ततिप्रश्नः॥ वागुरु राणितिथिः से
का वारयोगसमन्विता। छि २ भाजिता वयहत्ते शून्यं त्रि ३ ध्रुवेद ध भिभाजितम्॥२॥ ए
क १ शेषे विराद्भावी द्वि २ शेषे सम्भवोपिन। अवशेषो वृ कालेन सन्ततिः त्रिशेषके॥३
॥ द्वितीयोद्भाहितायां तु सन्ततिर्वेद ४ शेषके॥ ॥ अस्या गर्भोस्ति वा न वेति प्रश्नः॥ वा
र तिथि ३ गुणितैः कार्यं तिथिनाथो मतो हरेत्। द्वाभ्यां शेषे विधा १ वस्तिक रश्नास्तीति
निश्चयम्॥४॥ ॥ कति मासा जाताइति प्रश्नः॥ प्रश्नकवर्णा दशा १० संगुणा स्तेनंदा ९ १२
वशिष्टाः फलशेषयोगः॥ नन्दै ९ र्विभक्तः फलशेषयोगस्तेवं स्थिरगर्भगतास्तु मासाः

॥५॥ ॥ अथ गुर्विणी वा कन्येति प्रश्नः॥ तिथिवारर्क्षसंयोगो गुर्विणीनामसंयुतः॥
त्रि ३ शिष्टस्तत्र पुं १ कन्या २ गर्भनाशः ३ क्रमात्स्मृतः॥६॥ ॥ अन्यप्रकारः॥ नामर्क्ष
वतिथिश्चैव वारः प्रश्नाक्षराणि च। एकीकृत्य हरेत् सैः ७ स्त्रीपुमांसौ समान्वयाः
॥७॥ गुर्विणीनामवर्णास्तु गुणित ७ घ्नाद्वि २ गुणाः पुनः। तिथियुक्ता भिहृ ९ तशेषः स
मे स्त्री विषमे नरः॥८॥ ॥ पुनश्चान्यप्रकारः॥ नामवर्णान्वेद २० गुणा तिथिवार
न्विताः पुनः। निरेकाः नवभि ९ शिष्टाः समे स्त्री विषमे नरः॥९॥ ॥ पुनरपि चान्य
७ प्रकारः। पंक्तिः प्रश्नाक्षराणि रवकर मित २० गुणा द्वाग्नि ३० युक्ता तुरङ्गै र्भक्ता शेष
शुनः स्याद्दिनमणिशिष्टपृथिवीपुत्रादेवज्यतुल्यः। कंन्यादेत्याधिराजार्किन पदरजनी

नाथतुल्यैः सघसाद्र स्तारावुत्रौ । किंतु ल्येस्फुट मितिपठितं वक्रपाशादिचिह्नेन ॥ ०
॥ ॥ अथ स्वस्यान्यस्य वेति प्रश्नः ॥ प्रोगः पंचपगुणो वारयुतो रामाद्वशेषितः ।
चंद्रे १ स्वस्य करे २ ऽन्यस्यागते ० शुक्रयोर्द्वयो ॥ १ ॥ ॥ आयुः कतिवर्तत इति प्र
श्नः ॥ प्रश्नाक्षमात्रागुणिताः प्रहत्या २२ नागा प्रवद्वैः १० ८ विहृतास्य शेषं महार
वसुद्धं भवतीह वायुस्तीक्ष्णांशु १२ वर्षाभिहता कथितं स्यात् ॥ २ ॥ ॥ अथ पुंस्त्री
योर्मरणप्रश्नः ॥ नामाक्षराणि चात्राक्षदंपत्योरेकतः कृत । त्रिभिर्हृते गुणैः शेषे
१ ० पुंमृतिः स्त्रीमृतिः क्रमे २ ॥ ३ ॥ स्वरयोगे पि वानेन प्रकारेणावलोकय । गौरी २३
मित्याह श्रीकण्ठस्तत्रैव पुत्रजयाशनीवे ॥ ४ ॥ ॥ अन्यप्रकारः ॥ अक्षरं द्विगुणं कृ

त्वा मात्रा कार्या चतुर्गुणा ॥ दंपत्योर्योगतस्त्र्याप्तं हीने नारी ० शीघ्र भौ क्रमे ॥ ५ ॥
॥ ॥ इति वक्रपाशादिविनोदशुभपदश्रीदेवप्रश्नतंत्रे । उद्वाहादिकप्रश्नाध्याय
ह्रैतेषाद्दशाख्या ३ गात् ॥ ॥ अथ चिंताप्रश्नः ॥ दशा १० गुणिताः प्रश्नार्कीरवि १२ स
हिताः पंचपक्षगुणायुक्ताः । त्रिधा नवभक्ताः शेषतः तात्कालिकैः स्वचरः ॥
१ ॥ आदित्ये संस्थिते राजकुलविग्रहवेश्मनां चिंता । अथ शशिस्थे चंद्रे वैविधिकस्त्री
पुत्रसौख्यानाम् ॥ २ ॥ उर्वीपुत्रे स्थिते चिंता स्यात् क्षितिसपत्नैर्धान्यनाम् । सौम्ये प्र
गल्भतो योगभव मंगलानां वराणां स्यात् ॥ ३ ॥ जीवे विभवतनुजतीर्थगमधर्मशा ६
स्त्रशुभार्थी नाम । वीर्ये निधिरत्नविभ्रमनिसौख्यानां भार्गवे स्थिते ॥ ४ ॥ सौरिस्थिते

चिंतापापमहाभीतिवंधनादीनाम् ।इतिखलुदैवविदार्यैःकथयन्तिभृगुक्तंसदेहः
॥१५॥ ॥अन्यप्रकारः॥धातुमूलंतथाजीव त्रिरिशिष्टलग्नतोयथा।प्रष्टुराख्या
दिलग्नांतसंख्यानत्वादिभावतः॥१६॥ ॥अथशुभाशुभप्रश्नः।इष्टघटी६द्वि२गु
णाशरपभक्तावन्दू।शुनादिनवारनएवा।क्षा।शु२शु३वं४अ५प६हू६मे७क्रमतः
स्युःसौम्यखगाःशुभदोऽशुभदोऽन्यः॥७॥ ॥अन्यप्रकारः॥तिथिवारभयाम
संप्रयोगत्रि३हृतःसत्वरजस्तमोगुणाःस्युः।अष्टेषुषडेवसिद्धिर्वित्तक्षत
यत्तेषुफलानिसंभवन्ति॥८॥ ॥पुनरन्यप्रकारः॥प्रहूनामभूमिहस्तुमही २४
नैसैकभद्वि७विहतेगुरानवैं३।द्भमध्यापंशुगाद्वारे४।पवशुभंवैवन्दूहस्तग

गते२।३।०मरणंस्यात्॥९॥ ॥अथलाभालाभप्रश्नः॥सौम्याशुभान्याद्वितयं
तथात्मसूत्पितवैकोशुफलान्तिमोऽन्यः॥लाभलएकास्त्वमिपंयलाभालाभे
भविष्यद्विषयाविवार्यो॥१०॥ ॥अथविद्याप्रश्नः॥प्रश्नर्क्षयुक्तंत्रनिभंरसा
ढ्यंशेषरवबंद्रेव२दिविहृगुरो३कौ।पातालशृत्वीशुभिनेध।पगुहृष्याक्तोस्ति
न्गनैकोभवतीहविद्या॥११॥ ॥अथमैत्रीप्रश्नः॥तिथिवारर्क्षयोगस्तुसंगेना
ढ्याहतास्त्रिभिः३।सहितोभाजितोद्वाभ्यां२यन्द्वमैत्रीकरे२नहि॥१२॥ ॥अथा
स्मिन्वर्षेवृष्टिःप्रचुरावाऽल्पावेतिप्रश्नः॥वाकेत्रि३गुणितेद्वाभ्यां२युक्तेवारिधि
४भाजिते।शेषेसमे२।४भवेद्वृष्टिःप्रचुराविषमे१।३स्त्यिका॥१३॥ ॥अस्मिन्

मासेदिने वा वृष्टिर्भविष्यति वा नेति प्रश्नः॥ वृषकर्कटतौलिकीटनक्रघटमीनैक
नरस्थदा भवेद्वृ ७ ज १ युते द्वि २ युतेपि वा शशिरिविगादेव वृष्टिर्थो भविष्यतीति॥२४॥
॥ ॥कतिदिवसान्ते कतिदिवसे वा वर्षणं भविष्यतीति प्रश्नः॥ शिव ११ नग ७ शर ५
रामा ३ शुभा ८ नग ७ इषु ५ रस ६ दश १० भू १ द्वि २ युग ४ नग ७ गजा ८ श्री ४ षष्ठ ६ ह ८ रुद्र ११ इ
१५ वेदा ४ नव ९ दश १० शर ५ चन्द्र १ त्री ३ शशि ११ शैला ७ ह्यर्क्षाद्दवाधिदिन सम्महोप
र्षि नेववर्षणीपिया॥२५॥ ॥अन्यप्रकारः॥ कृत्तिथि १५ विधु १ दिना १ पर्क १२ द्वि २ युग २ ५
रामा ३ द्विज ४ शैल ७ क्षिति १ तिथि १५ नग ७ शीतांशु १ नेत्र ३ विश्व १३ युग रामा ३ रवि २५
१२ गुणा ३ नग ७ रामा ३ वह्रिर्हान्यि विश्व २ दस्र २ क्रान्ति धनवर्ष तुरगा तया द्वि नेववर्षिरो

पि॥२६॥ ॥दुर्भिक्षसुभिक्षप्रश्नः॥ देशाभिधानसंख्यान्ते कृतागतग्रहसंख्यया
युक्ता। दुर्भिक्षं वसुभिक्षं पक्ष २ विभक्ते क्रम १ द्व २ शेषे॥२७॥ ॥पुरादि वा प्रश्नः
॥ नामवर्णाः कृतिसंयुक्ता वेदयुताक्षरैः संयुक्ता नग ७ भाः तन्नाभि १ स्थो द्वि २
रथवयाद्भ ३ धाव रिभीतिर्यो पराजयदमनी ७ फलानि॥२८॥ ॥अर्घानुकूलं
समर्घं भविष्यति वा महर्घमिति प्रश्नः॥ संक्रान्तिषिष्ठितिथिवारसप्तव रात्रियु
क्तं गुणा ३ शेषितं च। वह्नि १ समर्घं समता करे तु २ शून्ये ० महर्घं मुनिभाषितम्॥
२९॥ ॥अयुक्तिपरायामिति प्रश्नः॥ कनकाधजे वगाविगोमहिषादिहि नरवानर
दिमिथुने। कर्के मोक्षपादि सिंहधात्वार तावादि कन्यायां॥३०॥ नार्या दिद्यके कर्मयोग॥

मा३५यासदुःखजेकीटे। चापे१५धादिघटैर्वैरि कंतोयोद्भवंशेषे०।२२।२१॥ ॥
अथ सेवकप्रश्नः॥ सेवकर्क्षशहितं प्रभुधिष्ण्यं आत्मयी कृतमपि स्वर७भक्तम्।
शेष०करेव८सफलं गुरौ३कुन्दे१ निष्फलं त्रितिहिलम्ब्रुफले स्यात्॥२३॥ ॥
अथ प्रष्टुर्विवक्षयाधनलाभप्रश्नः॥ पृथक्कृतौ सेवकसेव्यवर्गौ द्वक्रुसंगुणौ
वर्गपुत्रौ मिलितौ। नाग८वह्निहृतावि हवर्गभागे यदल्पाधिकं दं यमदशाहिनेन॥२५
॥ ॥अथ राजकृपाप्रश्नः॥ प्रष्टुर्नामत्रि३निघ्नं वघटीयुक्तं छिद्र२शेषितम्॥ वे २६
दे१राजकृपानस्यात्करे२राजकृपाधिका॥२४॥ ॥प्रष्टुर्विवक्षा भेदात्स्वामीकृ
पाप्रश्नः॥ तिथ्यंकवारादन३२अयुक्ता योगाग्निना नाग८विभाजितांशावेद१

कृपानैवकृपाकरे२३गतौ३कालेनवेदे४युक्तचिरं कृपास्यात्॥२५॥ नष्टर्क्षे नात्स्यात्
क्रकृपाद्वारे पंचे·नर्के६ प्रसादाभियुक्तोकृपाव। अत्यन्तभक्ता ऽकृपामही७
धापाद्रवेभभिता३अशेषे॥२६॥ ॥अथेतस्माद्रव्यप्राप्तिर्भविष्यतिवा नेति
प्रश्नः॥ गुरा३गुणितं प्रभुनामसेवकनाममिलितं गुरौः३हृतावशेष॥ वेदे१ प्राप्ति
द्विशेषनाप्तिः२व०स्याच्चिरेणैव॥२७॥ ॥अथपदप्राप्तिर्भविष्यतिवा नेति प्र
श्नः॥ सूर्याग्रहदृष्टग्रहयोगसत्वेन्दुग्रहदृष्टिविधुसूर्ययुवर्षे। स्यादुपदाप्तिर्भ
यत्रवापि योगद्वयवीर्याधिकान्यथाव॥२८॥ ॥पदस्थिरं वा नेति प्रश्नः॥ नंदे
न्दवो१९तिथिवारधिष्ण्ययुक्ता स्त्रि३भक्ताः फलानि शेषे। स्यान्नैस्थिरं कौ१चल
वै।

नोवरं स्याद्दसे शनयागौ३ तुवरं हि वायाम॥२८॥ ॥अथ बन्धमोक्षप्रश्नः॥ मेषेनु
लोग्नो यदि चन्द्रमाः स्यात् लग्नं हि कारणं हरगस्य मोक्षः॥ नक्रे बिलं वा द्रुतमेष स्थिरत्वं
धीरे कुलीरे प्रातिरेवतत्र॥३०॥ ॥अथानष्टो वादिनोमध्ये कोऽजयीति प्रश्नः॥वादि
नोर्द्वन्द्वयोः स्यामात्रा कारकबिन्दवः॥द्विरपंचपदि१० गुणाष्टयां योगे अधिक
यान् जयी॥३१॥ ॥अथ सन्यासयत्प्रश्नः॥लग्नेशानिष्टोपपश्येन्तुनिष्टो राशिः
शुभालिंगिनि पश्य हीनः॥लग्नेन शिष्टो दहनेन तुष्टो५ सत्याहि वार्ता कुकरे १॥२
त्वसत्या॥३२॥ ॥अथया॥साष्टलग्न८ ईगः सेकलग्न२ योगाशुभो यदि वा॥वार्ता २७
नद्दापि सत्या स्यादिति गोविन्दकुविधान॥३३॥ ॥अथ कौतुकार्थे गोष्ठीप्रश्नः॥

श्रीगणेशाय नमः॥ ॥ग्राहिप्रवाहे गमनादि सत्यं पूर्ण प्रवाहे न हि किंचनापि॥प
ष्टेप्रियस्या दहमान भागे स्थितेव भागे विफलं समस्तं॥ इतियात्रा॥ ॥संक्रान्त्यधर
नेसत्रादात्म भावधिग रायते॥त्रिकं३ षट्कं६ त्रिकं३ षट्कं६ त्रिकं३ षट्कं६ पुनःपुनः॥
पंथा भोगा व्यथा वस्त्र हानिश्च विपुलं धनं॥ षट्के भागे फलं षट्कं प्राप्ति मासि विचा
रयेत्॥ इति संक्रान्तिफलं॥ ॥शिरोमुखं कर्णनेत्रं स्पृष्ट्वा पृच्छति यो जनः॥ तुष्टो
धनधान्यानां लाभस्तस्य न संशयः॥ स्कंधग्रीवा हस्तौ च हस्तस्पर्शे लाभो हि दुःस्वर ॥
कुक्षि नाभिस्तनालं भे भस्य पानादि सिद्धाप्ति॥जंघालिंग कटिस्पर्शे कन्यालाभस्तु नो द्रवः
॥जानुगुल्फ पाद स्पर्शे महा भेरजना यते॥केशास्पर्शे भवेन्नष्टं पुरफलादि स्पर्शने शुभं॥
शरणागीरके संस्पर्शे कार्य सिद्धिर्भजायते॥कार्यं पंकपट स्पर्शे ग्रहपीडा मनो भयं॥अं

१०१६

गारामा॥ कक्षांडिस्यास्यर्शसिद्धिः॥ अतामते। देवगेहेनदीकूले दिव्यस्थाने शुभं भवेत्॥ छ
स्वंदिशुस्थितेसिद्धिर्विदिशुश्वनत्राप्यते॥ इत्यंगविद्या॥ ॥जन्मतारा चतुरणां तिथिवा
रसमन्वितः॥ ग्रहसंख्याहरेद्भागंशेषफलशुभाशुभं॥ भानुनाशोकसंतापश्चन्द्रां केक्षेमला
भयोः॥ भूसुतदुःखमाप्यानिबुधेप्रज्ञानमाप्यते॥ जीवेलाभमगोसौख्यं सूर्यपुत्रे महाभयं॥
राहुनाघातयानश्च केतुमृत्युर्नसंशयः॥ इति ग्रहवर्षदशा॥ ॥जन्मनक्षत्रीयथं नमशीलन
वमष्टिगणितेपीठे। दशाहङहलयेमाथङ्जचौठेहिङौहाय आयमवारहदिनेयाउकहोयं
डिनबक्रमाकमोभाव॥ ॥तिथियं चगुणीकृता वारनक्षत्रसंयुत। त्रिनयच्छमहाभागे ते
मंचन्द्रविचारयेत्॥ एकयानालगाभिमाप्तुन्यस्वर्गेयरक्षितं। द्वितीय मर्त्यलोकस्थे त्रैलो २९

ASHA ARCHIVES